DPN 6619

स्तोत्र संग्रह / STOTRASAṄGRAHA

Title :

Run. No. 7344 Cat. No. Micro. No.

Subject Stotra Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt.- New. / Maith.- New. / New.- Nep. /

Size in cms. 19 × 7 Folios 19 Lines (in a page) 6

Compl. / Incompl. Chapt. / act /

Author / translator Scribe / donor भवानिशंकर / हरिहरानन्दवैद्य

Date: NS / SS / VS / KS 789 Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water / one side yellow

Beginning, colophon, post-colophon : ॐ नमो: भगवते वासुदेवाय। ... इति शंकराचार्य विरचितं श्रीवि... जं भग-
१. इति वासिष्ठकृतं शिवाष्टक समाप्तं ॥ २. इति शंकराचार्य विरचितं श्रीवि... जं भग-
प्रयात समाप्त ॥ ३. इति शिवाण्ड पुराणे सप्तसत्या महादेव्या कवचं समाप्तं ॥ →

Colophon: —

४. इति सारदास्तव समाप्तं:॥ ५. केशव द्वादशनाम (स्तोत्र) समाप्त ५

६. इटि स्कन्दपुराण्य तुरशीस्तव समाप्तं ॥ ७. इति धर्म्मशावर्त्ति स्तोत्र समाप्तं:॥

॥ॐ नमो भगवते वासुदेवाय ॥ किन्नु नामसहस्राणि ॥ त्रिभुवनं नयायाश्रीदा ...निः॥

मवतिस्त्राः ॥ गनयापद्मसूत्रयश्च ॥ यथर्मेन्कुरुविविद्याः ॥ द्विपिर्दीपा... ॥

... ॥ नृसिंह यज्ञनारदः ॥ चतुर्वेदनयस्कृथाः ॥ ये ...मेद ... ॥

...स्तुमीन भूतदनी ॥ सप्रमेवाच्युदेवस्य ॥ वानालयेवचास्कमे ॥ नवर्मेन्द्र...

कासे ॥ केशवमर्दुः ॥ जनार्दन ॥ वरूस्य काकेन नामे ॥ द्वादशी श्रीधरल स्कथाः ॥ नं ॥

निद्धादशानामानि ॥ विष्णुपाकी विश्रियने ॥ प्रागन्न स्थायय ॥ १ ॥ की ॥ गस्यच नयरुस्तः ॥

करायहा ॥

...यनि सहस्रेन ॥ कन्यादानसहस्राणि च ॥ ...म्या वसहस्रेन ॥ ...

...नि च ॥ गवां कोटिसहस्राणि ॥ प्रायुवाद लसस्रमे ॥ ...मावास्यां युनमि

...कोटस्यायपस्कधान ॥ द्वादश्यां विविसरवन ॥ यथ ॥ कित्त्वमान ॥ २ ॥ सर्वश्रेया

...विनिर्मुक्ती ॥ विष्णुनाके भगच्छति ॥ श्रीः ॥ केशवद्वादशनामस्तोत्रं समाप्तं ॥ ७ ॥ ४

ॐ नमः शिवाय ॥ अथ मैकमकादेवं द्वीपियरुमरुध्यनी ॥ तृतियं ...वं नामे ॥ चतुर्थं वृषभ

...जी ॥ २ ॥ ...कलि वासः ॥ सप्तमं कामाजनासनी ॥ ...कमेदेवदेवं ॥ ...धम

धत्कर्मणः ॥ १२ ॥ नवमीवयिष्यन्नीनामं तदम्भैयार्थनिर्योरी दृश्यकौलंगनामी द्वादशीत्रि

वस्तुयम ॥ १३ ॥ तगाद्वादसनामानि त्रीण्यध्याय४य(१)त्तन्व ॥ १४ ॥ गंधयुक्षेव कृतपुष्पश्च

कस्तुवृतवनं न ॥ १४ ॥ १५ ॥ स्त्रीवानयान व्रत्सेवस्तनायानवृषयानि ४ स्व्यनागनम्धानी

र्थ्ये मूत्रविशस्यानकी ॥ १६ ॥ ७ ॥ ॥ शिवद्धा

२ भुर्ह्न्यजिन वसभकामसृजनः अमूत्रराजनः चालिवधर्वोधसारूपनका

मजतिष्ठसिनलकृति ॥ सगन्नाम्मग(सोक्तिर्निर्गमाकिर्लिराजिनधि, श्रीना

मत्रुधिकीक्तिनिकरास्थाननकृति ॥ २ ॥ ॥ ७ रा ॥ ॥

ॐ नमो भगवते वासुदेवाय ॥ सदानन्द उवाच ॥ नामाख्यालेकृ मायस्याध्यी ॥ मनिरवलूदे

वस्त्र पापानियानिविनयं वृत्थरुवमिचाक्षयो ॥ १ ॥ साकथंतुनमिलोके ४ यूजिनावन्दिह

गानहिन्दर्शननामियच्चवंरुनंकाडिगवान्दन ॥ २ ॥ धन्यास्क मानवालोका, यस्मिन्नवृ

यूंष्वे, न्यर्ष्किनीवगतन सालिरामनमिनायां थं तुनमियुस्वहिमुवो ॥ ३ ॥ तुलमियवि

ष्णुन्नक्ति, धन्योनत्तलपस्रेवं नकृणवार्थकलोयव, नापयन्किदूरुगल ॥ ४ ॥ किद्ध

स्तीयानिसंम्पृष्ट, मानेष्विरव । वेस्कवैन एवनीदलनदंव ॥ ४ यूजिनायनदेवै

यस्ताः ॥ ५ ॥ तीर्थयात्रादिगमने च किं कस्याभिर्नि सिमावयं च यद्वयन्किसिलम्मलिं । पुन
र्गिदलकामसी ॥ ६ ॥ समञ्जलिदलैर्युक्तं, कथं वायस्तमपुनः, कर्त्तव्यं कुश्चजनैर्यत्र
गया किंयत्समागमिः ॥ ७ ॥ स्नानदानं तथा धान्यं स्नागानकं सवार्द्धिन्नं तत्र भिकीर्त्तिता
लेसि निनयूर्थं स्यादपि कैरुल ॥ ८ ॥ पुनर्भिमङ्गरुवत्पूर्थं, यज्ञावविष्णुवल्लरस केश
वायवि चित्विदिता, सास्मिमस्तकस्य दस्तकं ॥ ९ ॥ ब्रह्मदंड समस्त वनिर्ही, पूज्यायामिज था
दलि च तथा कुलयविनाङ्ग, कलौमल्लविनाशनी ॥ १० ॥ मस्तुनाम नय च कूर्यात्

गृहित्वा पुनर्भिदत्तनं, पूयनं वासूदवाय, लक्ष्य कोटिगुनंल रुदा ॥ ११ ॥ यत्रलोक
दत्तनिर्था, प्रियं प्रीयं नलैहुरुनमूनय सिद्धि गन्धर्व्वा, यानालयन्नगेध्वना ॥ १२ ॥ कुंव
किसर्व्वे दवेच, किन्नला पुनसनमेन कृष्णा ॐ स्वदसमस्त्रा, सम्मूडमथ नयूलाध
पन ॥ १३ ॥ त्वमर्त्यमाजे पुनर्भि, वृष्टि मा विष्णु नागवयं, नग्नकूनस्यच दर्द्धुर्थं, कन्सस्य ॥
निधनायच ॥ १४ ॥ नायिनागेममनिनिय, स्वयं कृष्ण लयानीमानजगदिस्वान
पुनश्री, गवयिनि त्तनिदत्तवा ॥ १५ ॥ वसिष्ठ वचनात्पूर्व्व, लाभनसलयमदुटन॥

दगरीव, वद्वदाथायया नायिना उनगीवना ॥१८॥ वियाएगनामदद्यहो, थ्यअयर
किजनकामजा, नभुव्वकवनिकामरथ्य, नायिनाय्रस्तुसंगीनाथन ॥ गाक्वे नाः
थमुमादवि, युलावेवहिमालयगु ननायिनासनगेरांस्त्वा, उलगीय्रगमाय्यस
॥१९॥ य्रयाङ्गवनिनानिर्यं, कालनमाधवस्यच, ननायिना लंगीयादव्वा, गंगम
ङलसमीय्रगम ॥२॥ ज्यःक्वेनुसमीयरु, साविचाल्लापनाकुना, नयूध्यु नयन
मःम्होर्थं, गुउलगी ख्वांनमाय्यदं ॥२०॥ मर्व्वारिद्दवयविरि ४ किन्नरीरिख्वम

यिना नख्वप्रउमङ्ग्ला थाय, स्यवीना ख्वानमास्तुन ॥२१॥ धर्म्मान्नव्यगयवेश्वा
लायिनायिनि सीधस्वयं, सविणाउनगीपूध्या नस्वामिनादिनमिञ्चना ॥२२॥ लायिनाध
नामदवन, सिश्रीगालक्ष्म्यनवनसिगयायायिनारक्ष्या, धुउनगीदबुकामन ॥२३
कैलाश्यं व्यायिनिगंगा, यथाङगम्हाषुगियन ननथेवउनङीयाके, द्दस्यानसवनावं
ना ॥२४॥ नम्हाश्रीकिलिच्यायीं, श्रीकृयिनाउनस्याविना नउनगीवानीनाङमथंगा
नासंकुमरुनवा ॥२ गायनमहउनगीदेवि, सागनाङ्कुमगंकूगं नस्वामिकार्यरुह८

स्त्रेषु, सत्त्वमान्यूननागता ॥ २७ ॥ उत्तरं। गरुनंदम्भा, विम्बधायोनियामकनसद्वदाध
मृनिभद्दल, वम्भरस्यादिध्वधन ॥ २८ ॥ उत्तरं। कुगदिमं, संस्कार्यंत्रिनमाचरस्म
गंगोपुष्यामवाद्याप्तिं, दसक्षेनुरुलीयदा ॥ २९ ॥ उत्तरं। दममदंवीमि, वामिर्दरुलिवसील
नक्किलादमथनारलक्कु, उत्तरं। स्वींस्नानामरु ॥ २० ॥ वादध्यांजागरजकी, पतिस्वाउत्तर
ं। स्त्रवनद्यात्रिंशदयनाधश्च, ऊमगनस्यकंगव ॥ ३० ॥ उत्स्यार्यंऊँवननाल, कौमात्नवा
ई कंकृगानगर्सद्वम्विनर्येयानि, उत्तरं। यथनानूनी ॥ ३१ ॥ योगिमायानिदवस उत्त

स्नात्नस्त्रीददानिव नकूनूमठाउनागर्यै, स्वयंविद्याप्रयच्छति ॥ ३२ ॥ उत्तरं। नाममा
तनउपुष्पारवनिर्देस्यस्त नसस्त्रवानाक्षदवाप्ति, मूर्कीयच्छन्तिदक्षिनी ॥ ३३ ॥ उत्तरं।
स्त्रवसंऊँतुष्टंश्वरवीमिरुद्ददानिव नमद्यनहलयायार्थे, विष्कुनार्के ऊियगन्धनागु
॥ ३४ ॥ गदयस्मीनमुनिन्निरवी, लिखिनंवायिमस्कवेमनाश्रुरीविदस्यमस्य, मऊलीध
मूर्द्धुयऊँरु ॥ ३५ ॥ सर्वेतमऊँलीगस्य, नास्तिकिर्किंपमऊँनंनिश्चयंकगवरक्तिं
चिविदियागस्यवेक्कुवीं ॥ [illegible] ॥ जीवव्याधिर्विनिर्मुक्कं, धर्मीऊँवर्द्धंमेगमगो ॥ उत्तरं। स्त्र

वन्कुयी ७ गं. स्ऽ लेरावनिमानव ॥ ३९ ॥ निथकोप्तिस्ऽस्थानी. यँहँस्ऽ लेसमहाप्राणिध
यधिस्वाउनडीस्कव ॥ ३८ ॥ ॐ ब्रिस्कन्दपूना अउनगीस्कवसमार्थ ॥ ॥ गुरमुनु
स्ऽ नसा ४ शिवाय ॥ मनूयीफ स्वासिन ब्रह्माप्रश्न गिक गर्व. कनधर्म्मसम्बयली क
र्म्म नाजायगनक थं ४ ॥ रावारावकथंकन. कर्म्मनायायपृथ्वकं ॥ ब्रह्मा उवाच ॥ युष्मा
गुंषगनयुद्धे. सेंसालस्थउसावन नजम्यहँ मस्मारि. निर्व्वाणमायलमथ्वन ॥ ऽ
ब्रह्मकनवयाद्धवो. मुनि मिन्नमिगस्ऽ ल ४ याब्रे नीसहिगानूड ४ ॥ गनसँपनिव

निग ४ यक्ष किन्नर गन्धर्व्वा. सयय ध्याम्लागम ४ ॥ सिद्धि विद्याधरध्येव मनुनं यः
त्विसा रागनब्रयस्नुप्रनस्वरलुत्ता. यक्ष काग्रमानसध्वब्रह्म लाक गंवनेव. सु धर्म्म
कथत्यवे ॥ ॐ भुनडवाच ॥ भूब्रह्म न विक्रध्व. भूनूदवीरु नानन नसीसानधर्म्म
थिजानी. धन्यानि यलमास्कयी ॥ सत्याउ त्यद्धग धर्म्म. दयादानब्रयद्धग ४ ॥ क्षमायास्व
पयूर्द्ध्म. क्रा धल्लारोविनिर्ज्जिनी ४ ॥ सत्यम्यवपया धर्म्म. सत्यम्यवपलंगप ४ मस्य
नकर्म्मलसिद्धि. सत्यनपासौक्रनं ॥ ब्राह्मणोवाच ॥ जीधम्मूल्य थियालोक. कथं

सत्ये अर्धं गल नमरु अक्षाम नगायि, मारुमादि गमानस ॥ भुवनासुभु गंपुलीं वा
मक्रो धपियि गङ्काग्नि ॥ नजिवयूञ्यपापानि, सख्य ४ सोरनिवा लिगं ॥ विष्णुरुवाच ॥
पञ्चसुग कर्थसाधय्ज्ञान ४ वे ४ याग विद्याग ॥ धावधावे नसानायि नामादि ४ निय
वगच्छुनि ॥ ब्रह्माउवाच ॥ नाधनकन धर्म्मनि, लारमारु निपानिम, धाल नं पुष्प
ञ्चकि, नमक्रीपवमस्द ॥ ॐ भगवानुवाच ॥ निग्रहपञ्चसुगानि, नियरुकाथ
ममाहित ॥ निर्जिगाल्लारध्यषास्या, यन्त्रि क्रासल्लालिह ॥ पवयितानकलेवी

पल्लसस्यायि वर्जिमं ॥ अथ कार्दयनिरयज्ञ, गयाक्रियनमार्थकं ॥ यन्त इपसाद ४ रवा
ध्व, यनङ्गच्छासाङ्ग च्छुगायनदहासादरुयि, उत्तीमवक्रमङ्गुधि ॥ सहिं अय
नमा धर्म्मा, नास्ति किञ्चि ऊंगरुयत ॥ वनड व्यासाद्रि थधू, उत्त्वेयाया ॥ क्षिदुर्ग
का ॥ कृतक्रिनघ गश्वेन गिनलवनमाङ्गुनं ॥ भारतुमिस्वाञ्चवस्मानि ४ द्वियं
मनादिजालेंम ४ ॥ शुधात्मोनदर्देद्धन, दानेड व्यान्तूगभालिगं ४ ॥ गदानेमूलेम
रुकं नरावस्मायि नल्लल्लं, कनकासा गिल्लानागम, दाम्रिरुमिगहानिव ॥ विग

यक्षूज का। धनूजा द्यानं रावगत्यली॥ दवेविप्रायनिदकौ, रावस काम्लि नारुकोंगि
अृरावानिस्ह लीयाकं ननचयूच्य न्ह्युकोंग॥ ग्वयाकगं वंच्वेव, छ्वयेंनिजथाकि
यू॥ श्रुद्ध स्यनूरावन, ददेग वजउ स्ह्लतं॥ मर्द्दयन्के कवविष्णू, ब्रह्मा रवतुरिदव
ना॥ नाथियूच्येरूत (श्रुष्ठ नचराम्ह रथिरष्ठ कौ॥ विष्णू नूडवाव॥ यागक्वीयं वरिदा
स्वा, यवदव्यानिदथंके ॥ यनयिदानिगमाम्वि, यायिससायिकागनि॥ ब्रह्माडवाव॥
सोरामाहादिकामस्तु, यिश्वादम्हागमामिन॥ यार्थ्वतिडवाव॥ गोरस्का ब्रह्म थाम्वि,

ऊनविस्वाग घ्यागक नक्षत्रदालायदालिय, नम्लिव वालप्पाटन॥ अूसयाजिवघागि
व, वेकृदाहानियम्लिगन नसदानानि कर्म्मानि, किम्हलीयूच्य केलयि॥ कुंग्वलड
वाव॥ यायाल्मायायकर्म्मानि, नघ्ययूच्यनल स्वग ननसव्यवद गभवानि, गत्यकूले अनर्थ
क॥ स्हूर्द्धदव्यानूरावन, स्याकननगनिश्चय॥ श्रुयागउगु कूगठु, दाउन्कासस्हलेंम
स्ह॥ दानंनस्यनव्य ल्लाक, दानेगाकृविनागनं नदानेमावबुद्धिंच, दानंमाल्हाउगभथ
न॥ श्रेच्यायानाजिनड वोंउदिवाकृगमनथा॥ भानिकियूस्लिन रावन्कि, नउकादव

धर्म्मसाविव

यरु कनायकुसोयथनन्याम, चिन्कमानशुधिबयिनयागकीयङ्क्षरिङ्कृत्वा, सूयनना०स
न्मय४॥वियपाथागसाकालि, ङ४रवदालिङथागक४ायत्थमान्ध्यङ्कुनिङ्केव, निर्थे
स्नानरुलयदं नसस्मलङ्घमिन्माविरिलि, स्तुनिनाजमिदंमदुग्र॥ग्भङ्कुमिहमपानार
नि, रुलयाथ्याग्निमानव४॥ङुंनिधर्म्मन्माविङ्क्रिस्मागसमायर्के४॥ष्ठुरस्तुसवदाकान॥॥
१ङ्कुंनम४न्नेथ्यनायेश्रयुनमादवदवङ्ग, सद्वयरुनिवाविह्नं नन्नेथ्यनस्यसायध
थं, चिन्कयामासपोथिव॥नयूवंन्तुविरव्याना, जाजादनानथस्मन्पानचक्रवालि
४सविङ्कय, सपकधीयाधियारुवग्र॥क्रुलिकान्कनानिङ्क्षात्वा, दवङ्केङ्मयिगाङ्किस४॥
नाङ्किनीस्कदयिरवाऊ, ग्ननिर्यास्यानिसास्मुनी॥ग्भकठस्कदमिस्यर्के, सूनास्नरुयं
कवी॥द्वापन्नाङ्कुपरिङ्के, रावरिवान्किसूदासूनं४॥नगङ्कृत्वानगावावं, मन्क्रिरि४
सरुयाधिव४॥दन्ना॥न्थनगनग्रमा, रुयीरिनास्मनकन४॥वुवन्किसर्वलाकान्थ
पथमगत्समागन॥आवुल्लीवुऊगहक्ष्वा, यीवभ्ऊानयनादिकं॥ग्रयङ्कुयमगीनाजा,
वलिङ्क४यमूरवास्थिजी॥समाधानीकिसन्कान्कि, वुहिमान्थिजसलिमी॥वागिष्कडवा

वा॥ [illegible] आनीयत्ति नक्षयं, तस्मिन्नलि [illegible] मवुनयुजा॥ [illegible] नमसा [illegible] वृद्ध [illegible]
दिरि ४स्तद्द४॥ तदा साक्षि त्यमनसा, साहसीयवसीम [illegible] समा नायथन्नु दिव्य, दिव्या
युधमस्मन्वि नी॥ नधमास्त्र [illegible] वगन, गपानन्द पमर्छत्ती॥ समदयाजन नक, सर्वस्थाय
विसहित्व मा न [illegible] पृष्ठ मास्थाय, [illegible] नदा, नथउ कोश्च नौं [illegible] मानित्र
ल [illegible] यनमहसन् [illegible] स्येयूके, [illegible] कउसमक्षि [illegible] ॥ द्दी यस्मा नामसद्भाव [illegible] ४कि
नीठ [illegible] ञाकालै, [illegible] नाकाध्य [illegible] विनाय ॐ वरास्कवन ठ अुत [illegible] पूवि [illegible] सा

यनि॥ नवन्म सु धाय भंक्त वंक्तेनयनं वन्द्स्वकु नुगिरें॥ वन्दरु काजनाथ्यज्ञ्व वर्दवन्धे गिर्वेभाक नर

४ ह्नन्कथामय नाथ॥१२॥ ॥धवलवयुस्नामेन्धार्म्म दुलसनिवर्दु॥ रुजगवलयहालेन्माद्गिम्यामेमिंगे॥

नरुजिरायरुयानिंचानूचन्द्राद्वमालिं॥ हृदयकमलसत्थ्यसन्क गंचिकयामि॥ ह्नन्कथामयना थ॥१३॥

॥ ॥कलकलिंकुलूंभि कौमुदीत्मोनकमाभिं॥ हूरु नलविधलिभिरणवस्नुषानुस्तभि॥ भिवतिनि हृगिंगभि॥

छोलन्या ऊंगि॥ सकलइविनरुभिनौम्यरुमूकिलिभिं॥ ह्नन्कथामयनाथ॥१४॥ ॥कवचवदकुगवा

कर्म्मवाक्कायजिह्वा॥ शुवदनयनउम्वामानसं वायवाधं॥ विरिगस[illegible]रिगम्वासर्व्वमगव्हमम्बा [illegible]

यथनूनाद्व श्रीमहादेवकु॥ ह्नन्कथामयनाथ॥१७॥ ॥योगा [illegible] सर्वउनिजनिअमाने [illegible]

॥माध्यायत्वमम्नगवचनसा[illegible]या[illegible]वनाव॥ वसुन्धर्य कुवजनवनिग्यानिनानिर्द्दियर्ही॥ मास्गदवाइ

ममयगुयगउन्मजमान्कयवूह्नन्कथामयनाथ॥१७॥ ॥दंगिभक्त वावाद्यविललचिंगि स्वयवाधरू व४६

समाय॥ ॐ॥ ॥गुरुमसुसवकाकान॥गुरुसंसरुनदेस्माया७॥ हेव्वयह्न॥ मरूम्यांन्किथो॥ गुगुनेग

कुगं॥ वनिउाग॥ शनिन्ध्वनवासलां॥ थढिकुमूलिरिंगिरवानिभीस्वल४गुरु॥ ॐ॥ ७॥ ०॥ ध

र्ॐनम४भिवायश्रविक्वनायनवकार्क्षवमावहाय॥ ह्नाधयुदायकदूधामन्नासागनाय॥ कर्यि

शिवसिसा

र्कूरधवलायजटाधराय, दालिद्रदुःखदहनाय, नमःशिवाय॥१॥ गौरिप्रियायरजनीशकलाध
राय, कालान्तकायभुजगाधिपकङ्कणाय, गङ्गाधरायगजराजविमर्दनाय, दालिद्रदुःखदहनायन
मःशिवाय॥२॥ भक्तिप्रियायभवरोगभयापहाय, दिव्यायदिव्यवसनायगुणान्वितायआगमागमयाय
निखिलागमसंस्तुताय, दालिद्रदुःखदहनायनमःशिवाय॥३॥ चर्माम्बरायशवभस्मविलेपनाय
भालेक्षणायमणिकुण्डलमण्डिताय, मञ्जीरपादयुगराजवृषध्वजाय, दालिद्रदुःखदहनायनमःशि
वाय॥४॥ पञ्चाननायफणिराजविभूषणाय, स्वर्णायवर्णरुचलदायविरूपिताय, आनन्दभूमिवरदाय

नरयवन्दिताय, दालिद्रदुःखदहनायनमःशिवाय॥५॥ भानुप्रियायभवसागरतारणाय, का
लान्तकायकमलासनपूजिताय, नेत्रत्रयायशुभलक्षणलक्षिताय, दालिद्रदुःखदहनायनमः
शिवाय॥६॥ रामप्रियायरघुनाथवरप्रदाय, नागप्रियायनरकार्णवतारकाय, पुण्यायपुण्यभरिताय
सुरार्चिताय, दालिद्रदुःखदहनायनमःशिवाय॥७॥ मुक्तेश्वरायफलदायगणेश्वराय, गीतप्रियायवृष
भेश्वरवाहनाय, मातङ्गचर्मवसनायमहेश्वराय, दालिद्रदुःखदहनायनमःशिवाय॥८॥ वसिष्ठेनकृतं
स्तोत्रंसर्वरोगनिवारणं, सर्वकर्मप्रदंनृणां, रुद्राक्षकोटिविनाशनी॥९॥ स्मरद्रुद्राम्बसुनायायधः

श्रीवालगुरुगणस्तग,नायच(०स्प्यमोर(क्षा,शिवस्तायुस्त्रामाप्नुयात् ॥१०॥ इति श्रीवसिष्ठकृतं शिवाक
कस्तवं समाप्तं ॥ श्रीं ॥ ॐ नमो भगवते वासुदेवाय ॥ चिदानन्दं विशुद्धं निर्मलं निर्विकल्पं निर्लिङ्गं निराका
रमाकाशगम्यं गुरुज्ञानगम्यं ममव्यासकीर्तिश्रियं,यचैवब्रह्म ओंवदगम्यं नमस्ते ॥१॥ विशुद्धं शिवं ग्म
कृसाध्यं गुरुं नित्यं जगज्जीवनेशं गिरानन्दरूपं,सम्यग्दृश्यं कालत्रयवन्दनीयं त्रयीवक्रियमद
गम्यं नमस्ते ॥२॥ महायोगगम्यं निर्विकल्पसमानं,ध्वनिभ्यादिगर्भं क्षमकं किंकिणीकं क्रमस्थं गुरुनाम्नस्तकवि
इविंसिद्धऊसद्म,समासिनमाक्कं निर्विकल्पं सदा वन्दे ॥३॥ समानाधिकानेक सूर्येन्दुकोटिप्रकाशपूर्णप्र

त्यग्गिरद्रं नित्यविनिवानजीगिनवाह्नीस्वर्णवादाग्रे प्रसन्नं सदानन्दसम्वित्स्वरूपं ॥४॥ स्थूलं ... मूर्तिं
स्वरूपं ललाटे किलिठाविगाढ्ये चिनस्त्रिमूकर्णे तास्त्रव स्वगुरुं कारिणामायनान्द्रे,समस्तस्त्र
नत्वयस्वरूपा वर्गीत्री ॥५॥ ललस्त्रंठ लामक्तग धुस्त्र लांगे ऊवावागवोबाधवेंवा नूरुहासं सम्मलिब्याद
कृबामोत्तिमंकावमाली,सर्वानभस्त्रन कौस्तुभरूपकालरूपी ॥६॥ सनत्सोंगदेवनिवैवाद्दंदर्णद्रै
श्चऊर्ध्वलसत्कनालीकृगोंगे,सउकावादवालीकृगीयीगवस्त्र,यददद्वैद्दनिर्द्वन्द्वगयमोरिनामं
॥७॥ सर्वकंघुसंदर्शिनाकानमयं,सदासावयन्नसन्निशुद्धं निर्द्वन्द्वयास्त्र,सइनायन्नमायागि

नीसालयनी यत्नस्मेयवस्थायिनस्तैनमस्तु ॥ ८ ॥ श्रियासागकृतेपूगिम्नियुक्का स्थधनक्ष्मचतुर्भो
दलस्यामलांग्यसा कलत्रद्वयनामूनानाविनायसेलाक्षगरुडाय विष्णुनमस्तु ॥ ९ ॥ मवि वै
कलत्रस्तूर्णवैष्णुवर्ग्गे यस्यर्थ नैसकारु त्वंकुर्वंचता समस्तैयवि स्वश्च लाकस्य सका । गमिष्यामि इ
खनइ वीकिवद्दी ॥ १० ॥ जयर्यीयि साविचस्ता डिवभाभ । न्चडामालि नकौदिमौसव । वैचन ज्जूलादि
वसीद्यमिदि नानूकम्विन् । किमद्यायिदैनभायाकामिनद्यी ॥ ११ ॥ कस्याह गा ल्लत्वनक्ष्मसव
ग । यथाविम्न नन्तर्झमस्मीक्षि वैधी लाविविस्यारुमस्या मसत्याम वक्षौ । विश्व मिपुरंगे कि कि धा

मियस्तिदा ॥ १२ ॥ लयन्नद्यगानैदक्षाविंदविष्णु । मवावैरुनेनाथनानायट नमि । मायथानूस
नैष्यामिरुक्ष्णारु वीर्ने । नथभदयाणीलयदवयसीद ॥ १३ ॥ कृपालाद्रु नक्षगवासयरुमा । जगन्ना
धनानायक्ष्मनदविष्णु । सानमस्तु त्वंमि स्वालयननैमहत्मा गुनश्रीयनस्वस्वपाक्षाजगरुक्ष्मा ॥ १४ ॥
नमस्तुनमस्ते जगन्नाथविष्णु नमस्तुनमस्ते गदाचक्रपाणे सानमस्तु नमस्तु यय न्वालिस्तानि न्
समस्तायनाथे क्षसस्वाखिविघ्नं ॥ १५ ॥ मूरवसीदकासीनरवस्तुमाधौ कृमचा बूवक्षैसयमभ्र रिवेमं ता
तुजै गजमयानीरुजवैगनाथैदुनमनादवैनमन्यनमस्या ॥ १६ ॥ स्वर्ग गन्धा नीयट ० इसु रक्षा समाधा

शाम

यश्चिरुरुवीनम्बाल॥ समार्द्र विलायास्त्युष्मखसाह्नसमाश्रित्याया गीयगरयनृत्सर्वे॥ ११॥ ह्रङ्गिणीः
कुनाचार्थ विचविगीश्री … ग्रगयथाणसमाय॥ श्रीकृष्ण॥ ७ ॥ शुरुमकृसवदाकाल॥ शुरु॥ …
ॐ नमः श्रीगणेश्वनायाय … अदेवदेवश सर्व्वयद निवालनी॥ … र्थी चिन
यामासयाथिव॥ … रव्याणां आजादगलधश्चयुना॥
ॐ नमः श्री … उवाच॥ सर्व्वमक्षत्लमाक्षिल्य सर्व्वनृगणिवीवकलीनकवद
याल्वीलैनादव्या सर्व्वायायिपक्रुचानं॥ १ ॥ गीनीम…थानव्य शिवसदुर्गमयि वा
नप्रगासनस्थ चामूर्त्ती नाल्लाहिमहिषासना॥ २ ॥ जेन्द्रादविशआरूढा वैष्णवीगरुड

१६ …

।शिवकवच

सनानमाह्रश्चवीह … ।कौमानी … विवाहना॥ ३ ॥ ब्रह्मायणीहंससमारूढा सह
रुनक्षकुधिगानव … य … विमानस्था वनयरुववाशुधा॥ ४ ॥ दिव्यानादरुनाश्चाय
रुकानामरायंव … ह माद्वदवश्री सर्व्वकुगणिवेकनी॥ ५ ॥ याचारनवरुसमारू
ढी आग्नयामेषवाहे … किलानिषवबालाही नैऋत्यांरवङ्गधारिणी॥ ६ ॥ यगिश्च्यांवा
रुनीनरू वायूव्यांम्ह … हिली उदिच्यां लरू ४ कौवनी ऐशान्यां शूलधारिणी॥ ७ ॥ ऊर्द्ध
ब्रह्माणीमनरू दधा … वैष्णवी मनवेदसदिशालरू ज्ञामूण्डासववाहना॥ ८॥

पा २

जयामवारान ४ स्थाउ, विजयास्कउयत्ष्ठक नऋजिता वामया र्ध्वउ, दक्षिनवायना
जिता।।८।।गियामेश्वागिनिलच्छ झ्नाम्र्झि ध्रिवक्षिनानमानाधनीललाउउरु वी
नदाघ्यगस्विनी।।१०।।तिनगावरु वीन्मध्ये, नाश्माद्धयनपाठिक नगौरिवनीनक्याम्भि
ध्ध्व, ध्यानयाघालवासिनी।।११।।कयावीकालिकानक्ष, स्वर्ण्भूनउकूम्क्वीनासिध
कायस्तृगन्धावड्उध्वष्टिवठ्यक्षिनी।।१२।।ऋषभचामनानक्ष, ऊक्षायांवसनस्वगि
नदन्कानयंउ कौमानी, कल्नुनक्षेउचर्ल्लिका ४।।१३।।घल्लिकाविनघश्चाव, महाम

वगानुकैंनकाम्नकाविन्कंलच्छ, घावनंसर्व्वमअ्रीला।।१४।।श्रीवायारुद्रकान
न्यष्ठवंत्धाधनूर्द्धवी, नीवगीवावाङ्कैल्नु, ललीगाननवन्नुवच।।१५।।स्वेधया४रव
न्नरुस्माव, वाद्धागवजधानिवी नरुस्मयार्द्धनुरुस्माच, वंगुत्यामम्विकानथा ४।।
।।१६।।नरवासुलम्वनीनक्ष, त्नुम्कोनायेश्वनीनथा, स्मनीनक्षमहादेवि, मनसिच्छ ४
कान्मासिनी।।१७।।हृदयललितादेवी, उदलनुझवासिनीननारिकामम्बिकान
क्ष, शुञ्जैगुप्लश्वनीनथा ४।।१८।।दर्भाश्वर्उवमनक्ष, लक्ष्मीरगवनिनथान

अथमातावलायाका, जानुमध्येविनायका ॥१९॥ गुह्येयान्तौ नसिंहीव, पाद
पृष्ठमण्डसा अयाप्रार्जुनी ह्वबानन्दो, स्याद्धक्षकलवोसिनी ॥२०॥ दक्षिणे कद
लानीनरवोनन्दी, रूक्षमूर्द्धनिकश्वनी नमक्षु यानिकोवनी, रुवंवद्भश्व
नीशुरा ॥२१॥ नक्षत्रजावसामध्ये, दक्षिमध्ये पार्श्वनी नश्रुक्षनिकाल
लाशिव, जिर्लक्षमक्षु टश्वनी ॥२२॥ यद्भावनियत्रकोणे, कस्तूतामनिस
ध्य नद्यालामूरवी नरवाद्याल, दर्शुद्यासर्वसचीषु ॥२३॥ शुक्रश्वनिमलक,

ह्यायाद्वतश्वनी नध्यनमनाटकालवुद्धिर्भ, नक्षमधर्मध्यनिनि ॥२४॥ ग्रामेध्य,
नसमानश्व, ह्युदानाग्वानववन्नवा जिनीनक्षमसर्व, याणेकल्यसूत्ररुनी
॥२५॥ नसनूर्ये नध्यागन्ध, गर्दस्थ्यध्यवध्यागिनी, आयनकेउवानाली, धर्मान
कोउवेष्णवी ॥२६॥ यूधनकेउत्मरुालक्ष्मी, राज्ञानकेउरीनवी, विर्लनकेउवद्धा
नी, आयुधकिर्लिवनैजस ॥२७॥ यथध्यन्द्धानिभिनक्षो, नर्जायसर्वसङ्किना ॥४॥ सर्व
नजस्तमध्येव, नक्षन्नानायस्तीनधा ॥२८॥ नक्षादि नैजयस्थानं, वक्षि गैकवसनउभा

गि २

गत्सर्व्वनश्यत्मादेवी जयन्तियायनासिनि ॥२९॥ नश्यभ सर्व्वगमाणानी. दुर्ल्लभं ध्रुवमेप६
हानिनी. कुरुते कवचं दिव्यं. त्रिसंध्यमय४यत्थ त्त्तेन ॥३०॥ सर्व्वयायोर्विनिर्मुक्ते. भाकु६
नामपनाजिना ४ सर्व्वजि त्वाग्गुलम्बेवान. दानिष्टे नियूनाभनै ॥३१॥ यल्थदं कवच
वैधृत्वा. संग्रामभयविसत्तन ० समर्व्वदानिपूसर्व्वान्. निर्जित्यस्व गदं वजन्‌ ॥३२॥ ६
मरुम्भनन्तुनै कवचं. सपफ सत्यासम्मारु नैनजादौ उकवचं कृत्वा. पश्चात्सपफसर्गै६
जयन्‌ ॥३३॥ ससिद्धि राजनानित्यं. नैलाक्यातु न विक्रमेन रत्नानामच्चगरीना. द६

द्वाम्च्यगिवच्यनात्‌ ॥३४॥ नानागम्लीमन्त्राम नागमद्वनार्थिनरान धनैनविद्यार्थीन
नविद्या. मरांव्यालरानास्त्रियं ॥३५॥ अपूर्णानराणं यपूर्णं. समती यस्कुकीर्त्तिनं नै
कुष्मिनैलरागकामं. रांवस्तुयनितल्लरा ॥३६॥ सर्व्वयाथेश्वयमच्यन्ते. सफजन्मकृ६
नैनपि४ ॥ इति निगिवा गुपुनारासफसत्यामसादव्याकवचं समाप्तं ४ ॥ ॥ ॥ ६
स्वस्ति श्रीसम्वत्‌ ११९६ आश्विनमास. कृष्णपक्ष. नडाम्याँ तिथौ. उत्तरसभरवनक्षत्र. शुक्रयोगे
ग. शुक्रवासर. थ्वनिदिनकुन्हु. सिधूरा. लिखितरचानिकरवलछुरा. मस्कुसेवदा ॥ ॥

ॐ नमः श्रीसारस्वत्यै देव्यै ॥ नमस्ते सारदादेवी, कास्मीलपुलवासिनी, त्वं हं प्रार्थये
यादेवि, विद्यादानञ्च देहि मे ॥१॥ वस्त्रयलिसमासिनी, यश्चपुष्पकधालनी, नाऽज्य
चीगुनोयमा, सर्वरत्नस्वरूपिनी ॥२॥ शुक्लाम्बलधलिदवि, वेनारुक्सासनस्थुनी, लि
ङ्गितिद्धियदादेवी, वागीश्वलिनमस्तुते ॥३॥ कतनामयमदादेवी, मित्यानित्युगुह
नीप्रमा, सूक्ष्मविचिकलारास्ता, सुखवानावनमन्निता ॥४॥ प्रसिदतयदेदेवी, प्रसि
द्धसुवनरेश्वरी, त्रैलोक्यवामयिरुलुप्य सिद्धेदलिवलुर्थ ॥५॥ नमास्तु तस्मै

नन्दसुह्मानीवलदायनी, सर्वकार्यस्तुसैलली, सर्वसर्वस्वसुरुदा ॥६॥ प्रियव्रतं
रूलदादेवी, सुवस्तयहदायमे, वागीश्वनीमरुदेवी, संसारार्णवगालनी ॥७॥ ना
गसागजनाद्यापि, सुक्तान्धरुयस्तावनी, वन्धस्यन्दकलिदवि, तानानुयनमास्तुते,
॥८॥ सपजर्सकृतेदायं, सूत्रगमलनादापि, तसर्वनस्यनश्रीपी, तनमन्त्रोसम्बः
न्धिनी ॥९॥ इदं स्तवं महत्पुण्यं, बुद्धियस्तुयपर्वद्धनं, प्रायूलालास्तु विद्वे ... ऽस
विद्याप्रवर्द्धनं ॥१०॥ इति सारस्वतस्तव समाप्तं ॥ ॥ शुरानस्तु ... ॥